M. T. B. COLLEGE, SURAT

Manuscripts Library

No. Ref.

Ser. 1086

Title: Mrit Sanjibini Mantra

1086

Complete

Mrat Sanjivini Mantra		Title
		Author
		Editor
810		Year, Vols.
		Publisher
1086		Remarks

मंत्रोस्ति प्रत्ययो लोके यः शब्दानुगमादृते। अनुविद्धमिव ज्ञानं सर्वं शब्देन गम्यते। शोधकस्यैवात्मनो न्वेदो
दार्थावपृथक्स्थितौ॥ ॥ स्वात्मैव देवता प्रोक्ता मनोज्ञा विश्वविग्रहा। न्यासस्तद्देवतात्मता
हंसस्याष्टाक्षरस्यापि तथा पंचाक्षरस्य तु। एकद्व्यादिबीजस्य सिद्धादीन्नैव शोधयेत्। तथा। एकत्रिपंच
सप्तार्णनवरुद्रषडर्णके। द्वात्रिंशदक्षरे मंत्रे नांशकं परिगण्यते। गारुडादिषु सौरेषु वैष्णवे बौद्धजैनयोः। म
हाक्षरेषु मंत्रेषु नैव सिद्धादिशोधनं। चत्वारिंशदक्षरस्योर्ध्वमेकैकाक्षरवर्द्धितः। त्रिषष्टिबीजपर्यंतं मंत्रोनेक
फलप्रदः। एतद्व्यतिरिक्ते त्ववश्यकं शोधनं। यदुक्तं। मंत्रो वा यदि वा विद्या स्तवो वा सूक्तमेव वा। अर्थवंधु
शरीरस्य नाशको भवति क्षणात्। तस्मात्सर्वप्रयत्नेन दुष्टं सर्वत्र वर्जयेत्। न केवलं तु मंत्राणां विशेषेण तु दे
हिनां। परस्परं समीक्ष्यास्यात्संबंधो नान्यथा भवेत्। यस्तु सिद्धादिभिर्मंत्रो न भिलति तत्र प्रकारांतरमुक्तं।
पदार्थः। एषु दोषेषु सर्वत्र मायां कामं तथापि वा। क्षिप्त्वा वाद्यौ श्रियं दद्यात् न दूषणं विमुक्तये इति। तथा।
तारसंपुटितो वापि दुष्टमंत्रोऽथ सिद्ध्यति। यत्र यस्य भवेद्भक्तिः सोपि मंत्रोस्य सिद्ध्यति। तथा। मायाबीजस
मायुक्तः क्षिप्रसिद्धिप्रदो भवेत्। तथा। अनुलोमविलोमस्थं कृत्वाथवा वर्णमालया। प्रत्येकवर्णयुक्मंत्रा
जप्याः स्युः क्षिप्रसिद्धिदाः। वेदैर्मंत्रा अपि तथा [illegible] मन्येमंत्राः किं पुनः॥ ॥
दोर्भ्यां पद्भ्यां च जानुभ्यां उरसा शिरसा दृशा। मनसा वचसा चेति प्रणामोष्टांग ईरितः। बाहुभ्यां च
सजानुभ्यां शिरसा वचसा धिया। पंचांगकः प्रणामः स्यात्सर्वत्र प्रवराविमो। मरीचं मरिचं तथा
त्येकादशे पटले।

चिन्मयस्याद्वितीयस्य निष्कलस्याशरीरिणः। उपासकानां कार्यार्थं ब्रह्मणो रूपकल्पना। रूपस्थानां दे
वतानां पुंस्त्र्यंगास्त्रादिकल्पना॥ ॥
प्रणवव्याहृतिप्रासादमृत्युंजयत्र्यंबकमृत्युंजयप्रासादव्याहृतिप्रणवैर्मृतसंजीविनीमंत्रः
अथ न्यासः। प्रणवव्याहृतिप्रासादमृत्युंजयपूर्वकैर्मंत्राक्षराणि पठित्वा नमो भगवते रुद्राय
शूलपाणये स्वाहा हृदयं १ अमृतमूर्तये मां जीवय शिरः २ चंद्रशिरसे जटिने स्वाहा शिखायै
त्रिपुरांतकाय हां हीं कवचं ४ त्रिलोचनाय ऋग्यजुःसामने त्राय नेत्रं ५ अग्नित्रयाय ज्वल ज्वल मां
रक्ष रक्ष अघोरास्त्राय अस्त्रं ६। प्रणवप्रासादमृत्युंजयव्याहृतिसंपुटं मंत्रं न्यासेपितथे
त्रिपदार्थादर्शी॥ ध्यात्वा लिंगपंचास्यमुख्यं बुद्धिशक्तिमुद्राः प्रदर्शयेत्। नमोऽस्तु स्थाणुभूताय.
आगताय तथार्घ्यं यांल्लातुमासनगाय च। प्रजातोगं तु कामस्य दद्यादर्घ्यं विचक्षणः। आगतेस्वा
न काले च नैवेद्योपक्रमे तथा। पाद्यस्यापि समुद्दिष्टः समयस्त्रिविधो बुधैः। सिद्धार्थमक्षतं चैव दू
र्वा तिलमेव च। यवं गंधं फलं पुष्पमष्टांगमर्घ्यमुच्यते। पाद्ये च मधुपर्के च स्नाने वस्त्रोपवीतयोः
नेजने चाचमं देयं सुधिया परमात्मने। शतं सहस्रमयुतं शतत्वा वाप्यभिषेचयेत्। सौवर्णं रौप्यं
र्मितेनैव सपुष्पेण च देवतां। आर्द्रत्वचं समच्छेदांतर्ज्ज्यंगुलिवर्तुलं। समिधं होमयेत् प्रातः प्रा
ति विपुलां श्रियं। जपादौ सर्वमंत्राणां विन्यासं न लिपेर्विना। कृतं तत्क्रियाः फलं याति तस्मात्सर्वां लिपिं न्यसेत्।